CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library
S.D.P.B.
Coll. No. 935

Title Batuka Stavarāja.

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 935 Subject: Stotra.

Title: Batuka stavarāja.

Author: — Scribe: —

Date of the work: — Date of the Ms.: —

Place of the work: — Place of the Ms.: —

Size: 7" by 4". Extent: 4 foll.

Language: Sanskrit. Script: Devanāgarī

Remarks: —

॥श्रीगणेशायनमः॥ श्रीगुरवेनमः॥ कैलासशिखरासीनं
देवदेवंजगद्गुरुं॥ शंकरंपरिपप्रछपार्वतीपरमेश्वरं॥१॥ श्रीपार्व
त्युवाच॥ ॥भगवन्सर्वधर्मज्ञसर्वशास्त्रागमादिषु। आपदुद्धा
रणंमंत्रंसर्वसिद्धिप्रदंनृणां॥२॥ सर्वेषांचैवभूतानांहितार्थंवांछि
तंमया॥ विशेषतस्तुराज्ञांवैशांतिपुष्टिप्रसाधनं॥ अंगन्याससक
रन्यासबीजन्याससमन्वितं॥ वक्तुमर्हसिदेवेशममहर्षविव
र्द्धनं॥ श्रीमहादेवोवाच॥ शृणुदेविमहामंत्रमापदुद्धारहेतुकं
वैर सर्वदुःखप्रशमनंसर्वशत्रुनिबर्हणं॥ अपस्मारादिरोगाणांज्व
रादीनांविशेषतः॥ नाशनंस्मृतिमात्रेणमंत्रराजमिमंप्रिये॥
ग्रहराजभयानांचनाशनंसुखवर्द्धनं॥ स्नेहाद्वक्ष्यामितंमंत्र

राज्यभोगप्रदं
सर्वसारमिमं प्रिये ॥ सर्वकामार्थदं मन्त्रं ~~सर्वसार~~मिमं प्रि-
ये ॥ श्रुत्वा पूर्वमभ्यार्य देवी प्रणवमुच्चरन् ॥ बटुकायेति वै
पश्चादापदुद्धारणाय च ॥ कुरु कुरु द्वयं ततः पश्चाद् बटुका-
य ततः क्षिपेत् ॥ देवी प्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये ॥ मन्त्रो-
द्धारमिमं देवि त्रैलोक्यस्य सुदुर्लभं ॥ अप्रकाश्यमिमं मन्त्रं
सर्वसिद्धिसमन्वितं ॥ स्मरणादेव मन्त्रस्य भूतप्रेतपिशाच-
काः ॥ विद्रवन्ति भयार्ता वै कालरुद्रादिव प्रजाः ॥ पठेद्वा पाठ- ॥१॥
येद्वापि पूजयेद्वापि पुस्तकं ॥ नाग्निचौरभयं देवि ग्रहराजभ-
यं तथा ॥ न च मारीभयं तस्य न च नृपतेर्भयं तथा ॥ न शत्रुभो
भयं तस्य सर्वत्र सुखवान् भवेत् ॥ आयुरारोग्यमैश्वर्यं

पुत्रपौत्रादिसंपदः ॥ भवन्ति सततं तस्य पुस्तकस्यापि पू-
जनात् ॥ श्रीपार्वत्युवाच ॥ य एष भैरवो नाम आपदुद्धारको
मतः ॥ त्वया च कथितो देव भैरवकल्पमुत्तमः ॥ तस्य नामस-
हस्राणि अयुतान्यर्बुदानि च ॥ सारमुद्धृत्य तेषां वै नामाष्ट-
शतकं वद ॥ यत्त्वं संकीर्त्तयेद्देव सर्वदुःखनिबर्हणं ॥ स-
र्वान्कामानवाप्नोति साधकः सिद्धिमेव च ॥ शृणु देवि प्र-
वक्ष्यामि भैरवस्य महात्मनः ॥ आपदुद्धारकस्येह नामाष्ट-
शतमुत्तमं ॥ सर्वपापहरं पुण्यं सर्वापद्विनिवारणं ॥ सर्व-
कामार्थदं देवि साधकानां सुखावहं ॥ देहाङ्गन्यासकं चैव
पूर्वं कुर्यात् समाहितः ॥ भैरवं मूर्ध्नि विन्यस्य ललाटे भी-

मदर्शनं ॥ प्रमृणोत्पलाश्रयं न्यस्य वदने तीक्ष्णदर्शनं ॥ क्षेत्र
पं कर्णयोर्मध्ये क्षेत्रपालं हृदी न्यसेत् ॥ क्षेत्रज्ञं नाभिदेशे तु
ग्रां सर्वाघनाशनं ॥ त्रिनेत्रमूरुर्विन्यस्य जंघयो रक्तपाणिकं ॥
पादयोर्देवदेवेशं सर्वांगे वटुकं न्यसेत् ७ एवं न्यासविधिं कृत्वा
तदनंतरमुत्तमं ॥ नामाष्टशतकस्यास्य छंदोनुष्टुबुदाहृतं ॥ बृ
हदारण्यको नाम ऋषिश्च परिकीर्त्तितः ॥ देवता ऋषिता चेह
सद्भिर्वटुकभैरवः ॥ सर्वकामार्थसिद्ध्यर्थे विनियोगः प्रकीर्त्ति
तः ॥ ॥भैरवो भूतनाथश्च भूतात्मा भूतभावनः ॥ क्षेत्र ॥२॥
दः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ श्मसानवासी मांसा
सी खर्पराशी खरांतकृत् ॥ रक्तपः पानपः सिद्धः सिद्धिदः

सिद्धसेवितः ॥ करालः कालशमनः कलाकाष्ठातनुः कविः
त्रिनेत्रो बहुनेत्रश्च तथा पिंगललोचनः ॥ शूलपाणिः खड्ग
पाणिः कपाली धूम्रलोचनः ॥ अभीरुर्भैरवीनाथो भूतपो
योगिनीपतिः ॥ धनदो धनहारी च धनवान् प्रतिभानवान् ॥
नागहारो नागकेशो व्योमकेशः कपालभृत् ॥ कालः कपाल
च माली कमनीयः कलानिधिः ॥ त्रिलोचनो ज्वलन्नेत्रः त्रि
शिखी च त्रिलोकपात् ॥ त्रिवृत्तनयनो डिंभः शांतः शांतज
नप्रियः ॥ वटुको वटुवेशश्च खट्वांगवरधारकः ॥ भूताध्यक्षः
पशुपतिः भिक्षुकः परिचारकः ॥ धूर्तो दिगंबरः शौरिर्हरिणः पां
डुलोचनः ॥ प्रशांतः शांतिदः शुद्धः शंकरः प्रियबांधवः ॥ अष्ट

स्तुतिर्निधी शाश्वत शान च चतुस्तमोपह ॥ नमस्याधारवन्नाधा
रः सर्पयुक्तः श्रीशिख ॥ मृत्युरोगन्धराशी क्रोधपतिन्नेष
राक्षसः ॥ वंकालधारी मुण्डी च मां च यशोपवीतवान् ॥ ओं न
गोमा दुन रक्तनीमा रताः द्रोनएस्तथा ॥ शुक्रो नीलांजनप्रख्यो
देत्यराममुक्तभूषितः ॥ बलिन्द्रबलिनिता मा कामी काम पराक्रमः ॥
सवापचारकादुर्गोदुपन्नतानिषेवितः ॥ कामीकलानिधि श्रांतः
कामिनीवशकृद्वशी ॥ सर्वसिद्धिप्रदो वश्यः प्रविष्णुः प्रतापवा
न् ॥ ॥ ॥ अष्टोत्तरशतं नामस्ते रवुस्यमहातमन ॥ मयाते ॥ २ ॥
कथितं देवि रहस्यं सर्वकामिदं ॥ पठेद् पठति स्तोत्रं नामाष्टशत
मुत्तमं ॥ न तस्य दुरितं किंचित् न रोगो न भयं तथा ॥ न शत्रु
न्यो न यं किंचित् प्राप्नोति मानवः क्वचित् ॥ पातकस्यान्नयं

नैव पठेत्स्तोत्रं मनन्यधीः ॥ मारीजभयराजभये तथा चौराग्नि
जेभये ॥ अस्यातिक माहाघोरेन था दुःस्वप्नदर्शने ॥ बन्धने
च महाघोरे पठेत् स्तोत्रं समाहितः ॥ सर्वं प्रशममायाति नि
युतेरवकीर्तनात् ॥ एकादश सहस्रं तु पुरश्चरणमुच्यते ॥
ति संध्यं यः पठेद्देवि संवत्सरमतंद्रितः ॥ स सिद्धिं प्राप्नुयाद्दि
दुर्लभामपि मानुषः ॥ षण्मासान्भूमिवकमरस्कपठित्वा च नरो
दो ॥ राजा शत्रुविनाशाय जपेन्मासा द्वयं पुनः ॥ राज्ञो वा मन्त्रि
यं देवि नाशाय त्वद्वशीकृतवान् ॥ जपेन्मासत्रयं परो राजानं
वशमानयेत् ॥ धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः
पठेदष्टयं पठेद्वापामेवं तथा निष्टु ॥ धनं पुत्रांस्तथा दारा
न् प्राप्नुयान्नात्र संशयः ॥ रोगी रोगाद्विमुच्येत बद्धो मुच्ये

तव वंदनात्॥ नीतोत्तयाद्भिमुच्येत देवीस्तवनं संश्रयः।
यान्यान्समीहते कामान् तांस्तान्प्राप्नोति निश्चितं॥
अकाश्यमिदं गुह्यं न देयं यस्य कस्यचित्॥ सत्कुलीनाय
शांताय ज्ञानवेदं न वर्जितं॥ पयाप्रियशिष्याय पुत्राय बा
धवाय च॥ दद्यात्स्तोत्रमिदं पुण्यं सर्वकामफलप्रदं॥ ध्यानं च
ध्यामि देवस्य यथा ध्यात्वा पठेन्नरः॥ स्फटिकसंकाशं
सहस्रादित्यवर्चसं॥ ... त्रिनयनं चतुर्बाहुं द्विबा
हुकं॥ भुजंगमखलं देवमाग्नेयं शिरोरुहं॥ दिगंबरं कु
मारेशं बटुकाख्यं महाबलं॥ खट्वांगमसिपाशौ च शूलं चै
व तथा पुनः॥ डमरुं च कपालं च वरदं भुजगं तथा॥ नील
जीमूतसंकाशं नीलांजनचयप्रभं॥ दंष्ट्राकरालवदनं नूपु
रमेयसमन्वितं॥ ध्यात्वा जपेत् संहृष्टः सर्वान्कामानवा
प्नुयात्॥ स्तवराजं परमेश्वरी॥ ॥ इति श्री ...